॥ रनुष्टुप्छन्दः श्रीसिद्धिलक्ष्मीदेवता क्लीँ बीजं ह्रौँ शक्तिः ह्रः कीलकं पुरुषार्थचतुर्वर्गसाधने विनियो
गः॥ ॥सिद्धिलक्ष्मीः सिद्धिपूज्या · सिद्धरूपा शिवप्रिया ॥सिद्धेशी सिद्धमाताच · समस्त सिद्धिदायिनी॥
सुन्दरी चारुसर्वाङ्गी · स्वरूपा विमलानना ॥ नम्रनम्रप्रियानन्दा नम्ररूपा पराजिता । परा प्रियापराशक्तिः
शक्तिरूपा शिवप्रिया ॥ सिद्धेशी सिद्धिमाताच · समस्त सिद्धिदायिनी ॥ सिद्धिप्रिया सिद्धिदेवी ·
सिद्धमाता तथैवच ॥ शिवभार्याच देवेशी · शिवानी शिवरूपिणी । सर्वेशीच शिवः शान्तिः शान्त

आशा सफू कुथि ASHA ARCHIVES 1.817 I

सि·स·रूपाशिवालया।शिवदाशिवपूज्याच·शिवमातातथैवच।शिवपत्नीशिवप्राणा·शिवमान्याशिवप्रभुः
॥सर्वाणीसर्वभद्राच·सर्वपत्नीहरप्रिया।भवप्रियाभवानीच·भवरूपाकपालिनी।कपालधारिणी
चैव कपालदेहभूषणा।कपालीदेहसंलग्ना·खट्वांगधारिणीतथा।देवीचदेवमाताच·सर्वदे
वनमस्कृता।देवप्रियादेवरूपा·देववैरिविनाशिनी।देवपूज्यादेवमान्या·देवानांहितकारि राम:
णी॥इन्द्राणीचेन्द्रभार्याच·इन्द्रवैरिविनाशिनी।इन्द्रगोपनिभाचैव·सुरासुरनमस्कृता।हंसहंसग २

नग्निकानग्नरूपाच·दिगम्बरनितम्बिनी।आशांबरासूक्ष्मकटि·मेघनीलकचातथा।मञ्जुदेहा
मंजुगति·मंजुनूपुरशोभिता।कोमलाङ्गीपद्ममुखी·फुल्लपंकजलोचना।तरलाचंचलालो
ला·चंचलाक्षीनितम्बिनी।पीनोत्तुंगकुचातीव्रा·तीव्रवेगामनोहरा।सिंहरूपासिंहकटिः सिंहा
सननिवासिनी॥सिंहनेत्रासिंहरावा·सिंहतुल्यपराक्रमा।सिन्धुकन्यासिंधुजाचसिन्धुमध्य
निवासिनी।सिन्धुपूज्यासिन्धुपुत्री·सिन्धुरूपेणसंस्थिता।सिन्ध्वात्मजासिन्धुमातासप्रसि

सि·स· सुखस्वरूपिणी।अग्निभार्याचाग्निवधू·रग्निपत्न्यग्निवल्लभा।महीकन्यामहीपुत्री·महीजाभूमिरू
१० पिणी।भूमिजाभूमिकन्याच·भूमिरूपाधुरन्धरा।इज्याईज्याचेषुधरा·इषुरूपाघनस्तनी।वास
नावासनाहीना·निवृत्तिर्निर्वृत्तिःकृतिः।भ्रमणीभारतीभामा·विशोकाशोकहारिणी।वरेण्य
शीनाकुलीच·वेशिनीवृषरूपिणी।माधवीअरणीगोत्रापताकावासवप्रिया।विनीतावसुनी
ताच·नीतिसुक्तानतिप्रिया।कुक्कुटीसंकटाधीरा·कर्पटाकर्पटप्रिया।सुरंगाकोलिनीया राम:
म्या·कुलवर्त्मप्रकाशिनी।विकण्ठकीछिन्नमस्ता·लूनमस्ताचतापिनी।तपिनीधूजनीचैव· १०

विदग्धाविश्वरूपिणी।तमिस्रागह्वरादक्षा·दक्षपुत्रीजितेन्द्रिया।विश्वेश्वरीविश्वधात्री·व्याधिघ्नी
व्याधिनाशिनी।गूढातिगूढागोरूपा·मृगांकावनवासिनी।धूमावतीमहामारी·मालिनीहाट
केश्वरी।कनकाभामहानाला·क्षेत्रज्ञाक्षेत्रपालिका।गोकर्णाकाकजंघाच·घण्टारावाथ
मूषिका।चेतनाविष्णुमायाच·किरातीचमहाशयाः।सुरभीनन्दिनीभद्रा·वलभद्रनितम्बिनी
॥हालाप्रियाहरधरा·सारदाकामदायिनी।महामंत्रामन्त्ररूपा·शब्दब्रह्मस्वरूपिणी।कुबेर
गृहसंस्थाच·कुबेरधनरूपिणी।पुण्यकलापुण्यदेहा·तथापुण्यजनप्रिया।वाणीहंसाभूतपृ

सि.स. स्ता·चापहस्ताधनुर्धरा।अग्निज्वालाचोत्पलाक्षी·नीलोत्पलदलप्रभा।रम्भोर्वशीरहस्याव·रक्षोरूपाश्च
११ किन्नरी।सहस्रप्रेतराट्क्रोधा·सहस्राक्षनितम्बिनी॥सहस्ररश्मितेजःस्था·सहस्रांघ्रिभुजातथा।स
हस्रभानुसंकाशा·सहस्रब्रह्मसंछिन्नत।सहस्रइन्द्रसंहीव·सहस्रदेवप्रमाथिनी।त्रैलोक्यमो
हिनीमित्री·भुजंगपतिभूषणा।भोगाढ्याभोगरूपाच·भुजंगवलयातथा।विषयाविषरूपाचवि
षपानकरीतथा।विषभोक्त्रीकुरंगाक्षी·कुरङ्गपतिविक्रमा।विषपानरताविश्वा·कुलयाकुल रामः
नायिका।कुलजाकुलकान्ताच·कुलपाकुलितातथा।जयलक्ष्मीर्जयश्रीश्च·जयरूपातरंगि ११

नी।तपिनीह्लादिनीघण्टा·घण्टावादनतत्परा।घण्टारवप्रियाघर्मा·घर्मरूपादितिस्तथा।अ
दितिर्दैत्यसुजृम्भा·जृंभशत्रुनितम्बिनी।विहायसीत्रैदशीच·भौमीवासान्तनीतथा।शिक्षा
दीक्षाअनूढाच·कंकालीतैजसीतथा।सुरीदैत्यानागरीचनरीनाग्यासुरीश्वरी।लोहदण्ड
निष्कलंका·निर्मांसानिःस्वरूपिणी।दारिद्र्यनाशिनीदीर्घा·महतीरिपुमर्दनी॥उत्ताना
धोमुखीसुप्रा·वक्त्रन्याकुञ्चनीत्रुटिः।दम्भोरिहस्तादम्भोरिरशनिरशनिप्रिया।वर्णाती

सि·स· नाश्रमातीता · मृडानीमृडवल्लभा । वनेचरीभूतसेव्या · भूतेशी भूतनायिका । मृत्युञ्जयामृत्युहरी ·
१२ मृत्युंजयविलासिनी । मृत्युञ्जयवरारोहा · भक्तमृत्युविनाशिनी । अमृत्युमृत्युरूपा च · मृत्युरू
पेणासंस्थिता । प्रेमदाप्रेमरूपा च · अप्रमाप्रेमरूपिणी । अतनुःसुतनुस्तन्वी · तनुमध्यातनुस्त
ना । फेत्कारिणीदीर्घयुक्ता · भावनाभववल्लभा । प्रथमा च जघन्या च · मध्यस्थामध्यमा तथा ।
पृष्ठस्था च पुरस्था च · पार्श्वस्थोर्द्धतलस्थिता । नेदिस्था च गिरिस्था च वहिस्था च गुहाशया । परा रामः
परा च पश्यन्ती · अवेद्या वेद्यरूपिणी । व्यक्ता बाचिक वाचैव · उत्फुल्लाफुल्लरूपिणी । वन्ध्या १२

आशा सफूःकुथि
ASHA ARCHIVES
1.819 I